Shri Raghunatha Temple MSS. Library,
JAMMU

No. ३८२ घ

Title शृङ्गार कौतूहलम्

Author लालमणि:

Extent ७ प Age

Subject काव्य

© Dharmartha Trust J&K. Digitized by eGangotri

शृङ्गारकौतूहलम्

३८२

© Dharmartha Trust J&K. Digitized by eGangotri

नृपस्य विलासहेतोः स नभिरूपधि. तावि दधे विधात्रा॥ ९ ॥ हस्ताचुरो धक रिणि च शि जि मृनेत्रा
किंचिद्विकेचितमुखी वपुषा नमंती॥ आलिंगिता न वचकूर्णपिनीतमीता धूर्तेन किं चरमिते यमिलि
प्रतीमश॥ १०॥ [illegible] आरोपिता लिंगनचुंबनेन निष्कास्यस्य सर्वशयनेकथं चित॥ तन्व्याय
तावधिशनैः शनैः किंप्रियेन साभोद्धिधुरे नवीना॥ ११॥ नीविं निमुंच मम नाथ तवाग्नि हालीदीये
पुनः शमपदेशकपाद युग्मं॥ इत्थं नवोढरमणीयवचनैः सशंकैरातंदमेव बहुधा तरुलभजंते १२
श्वश्रूजनेषु नमिताननचंद्रबिंबा हेलाव ता सुमारवापु चमाभ्यसूया॥ आच्छादितो वट तनुः सहसा
नतांगी तज्जैव भाति नवसंगमसुप्रभाते॥ १३ रहः प्रदेशे रमसा छपानां समीक्ष्य मंदं समयैश्च समेत्य।
पपौ शनैः राष्ट्रमधुप्रहृष्टं दुदुंबवक्रं च नवोढवध्वाः १४ अधुभा कृतु दिनांतरे मयां देयमेव नीहिये
छरं अंसितालकमुगंधिन चिबुके। केचिता ननमम नोग मंजरीनिःसरतु षसिके चिसोधः॥ १६ उद्य
कुचुक ग्रंथिवंधन मुग्नं नीराजबिंबाधरं कांतप्रेमरसाज सा च्युग जव्व लासिभूषणं॥ आविर्भूति न
रवत्तलं विगलितं श्रीखंडपत्रावलि प्रातभाग्यवनोग्रहादभिसर त्येषान वा नागना १७ यांती निवेश्य
करमालिमुजे च सोधे हस्तांतरे निजमधापदं दधाना॥ मंदानि लाहतलुचांतरं कं पिचीना कस्य घ
सिद्धिरियमिदलुमरवानुलाने॥ १८ अकं [illegible] दुकपयोधरं भ्रमडुजाइयरूउ स्फुज सनमर्लनलि हास्मि तंर
विधेत चारुभूषांबरं। कंयास्त बन ता लितं प [illegible] कसं [illegible] स्वसौधपरिशोहितं म्सगाहशाकपंच
थिकलो १ लपति १९

© Dharmartha Trust J&K. Digitized by eGangotri

वक्षोतिविश्वस्तनं॥ लेपः स्नानसकांतिरकुवसनप्रद्योति शानीयश्च॥

श्टंगार० विम्राणानरवरलतांशुकजितं वक्षोतिविश्वस्तनं कुचान्तरवेयेमृगलोचनाविजयंते धन्यस्य कस्यति

२ यत्सं केगरुसार धूपधमनेमधूपयेती कुचान्तरवैयेमृगलोचनाविजयंते धन्यस्यकस्यति पल्पंकेगरुसारधूपधमनेमधूपयेती। विलासिनीषु पदाम्बुदं॥ कद्वाश शांनवलयं

री॥२०॥ईवदालकसमधारविनीलता रंजेद्यासहेदपरिणमतालसुपद्मावृंदं॥ २१ वक्तेनीकुरितेनचापिचपलादृष्टिनवुष्टि

नयनीजनंडाद्रुःनोकस्यहंति हृदयं तरुणादृदाना २२ वक्तेनीकुरितेनचापिचपलादृष्टिनवुष्टि नयनीजनंडाद्रुःनोकस्यहंतिहृदयं॥ धूलीकेलिनलापिनोव्यपगतानभ्र

स्तनेनौवामंदगतिर्नचापिमधुरावाणी स्मितोद्भासिनी॥ धूलीकेलिनलापिनोव्यपगतानभ्र

२ स्तनेनौवामंदगतिर्नचापिमधुरावाणी स्मितोद्भासिनी॥ हारिणी॥ २३॥ विलासिनिवचोमृतेपततिर्न

भ्राद्विभ्रमाक्षेपकैरपिहेतुभिविजयते प्रणामनोहारिणी॥ २३॥ विलासिनिवचोमृतेपततिर्न भ्राद्विभ्रमाक्षेपकेरपिहेतुभिविजयतेप्रणामनो हारिणी॥ ननु क्सिंतेकिमुसुधीवक्रेपरी

वक्र संतिरंनवावलतिचंचलातरललोचनेश्च लता १५दं चतिनवक्मितेकिमुसुधीवक्रेपरी

वक्र संतिरंनवावलतिचंचलातरललोचनेश्च लता यौवनं॥ २३॥ शोभामुखपंकजेसुललितंयानेचमंदालं

तनोतिनहिबेभवेल्वयिसमागते यौवनं॥ २३॥ शोभामुखपंकजेसुललितं यानेचमंदाल

७ तनोतिनहिबेभवेल्वयिसमागतेयौवनं भावगौबंधकोपमितं रदछदलं वक्षोजविस्त्रीक

सेरोमालीलतिकास्मितेबकुधंकि विनपाभावगौबंधकोपमितंरदछदलंवक्षोजविस्त्रीक वा ६

सेरोमालीलतिकास्मितेबकुधंकि शोजातेनवयौवने २४ धूर्तमौग्रन्धानवाकुलतया वक्षोजसंपी वा ६

लेकिंकिंकेवसुखायवंवलदृशोजातेनवयौवने २४ धूर्तमौग्रन्धानवाकुलतया वक्षोजसंपी

लेकिंकिंकेवसुखायवंवलदृशोजातेनवयौवने नहीयंरूपा॥ नोमेत्यादृत्तले लिपप्राणायिनीप्रायस्त्वितंसंम

र्दनंकिंवासिंचनवाम्रतेरतिभरेरंगोनहीयंरूपा॥ नोमेत्यादृत्तलेलिपप्राणायिनीप्रायस्त्वितंसंम राम

तंकोपंमानिनिकिंकरम यिवृथाकोपोभवन्मूकता २५ कोपितोगतनिशित्वयाप्रियस्त्वाम २

तंकोपंमानिनिकिंकरमयिवृथाकोपोभवन्मूकता २५ कोपितोगतनिशित्वयाप्रियस्त्वाम २

येव्यतिनवाघुमाधवश्च॥ गछतस्यसविधेत्वमेवसमानिनिप्रकृतिमंजुलंत्विदम्॥ २६

तरुणमतिमरत्नामेवमात्वांधकारेप्रतिदिप्रामतिगाटेमार्गमिन्वैयत्पाः॥ जनपरिजनयांकामामि

नोवारमीत्वास्तदिति युगपदासीत्सरत्वमवेरानुरागश्च॥ २७ हत्वाकेशानरवावविस्त्वनिविडेकसं

© Dharmartha Trust J&K. Digitized by eGangotri

२

रिकाले पनं देहस्य स्मितवी विताननमलं चाधापनीलांवरं। मंदंमदमुपेतिचेद्वदनानन्वेभिसारेपथिप्रा
यच्चं चलतो भयारस्तुगतैवेतः कुरंगीदृशः २८ सर्वांगिचंदनविलेपनमादधानामंदस्मितैर्विरचतीकुज
वामनेत्र।। आपातियातिनहि सामिषशीके मन्यमिपीनिनायरजनीषुविचारमूढा २९ सोयंमानवतीमि
दृहत्तमनानेपैतिकिवापवामार्गचोरभयादृनाहरवतः किंविस्मितंत्वा भवेत ।। किंवागताग्रतः प्रतीच्छ्
परस्त्वंवा वरप्रसुरं किंनायातिसखिप्रियोतिस्तुमगः शंकेतदेशस्यलम् ३० यीत्या स्वशीके तत्
गान्ता च्छिता स्विता ध्वनिजीवक्षन्येकीतः समालिंगन्मातवानप्रसंगमंभोरुहजो चनायाः ३१ गात्रं
रू० शीतविलुप्तकांतिनलिनीपत्रस्य धत्ते रुहशीवक्रं निश्वसितादूरं चारनिवारितापितुभगमानं किमर्थं
धाः ३२ अंगाभूषणानुसंतिप्रतिपदं पत्रातलीप्रोत्ततिप्रोटसाद्यूनकेनुकीदृढगुणानायातिवातोर
ण।। ताम्बूलंमुखसंपुटाद्‌तिशयंनिष्ठीवतेसुंदरीसायंकांतविलंबितत्वयिपरं सावांछया जीवति।। ३३।। दे
न वड़तास्मिसखिकेलिवनेद्युतत्रजातादृशायमितिकेड वशगादकस्मात्।। रक्तालिमिनरवपदानि भवं
तियानिगंतव्यमेवंमपायकदाचित ३४ खिन्नं वक्त्रसरोरुहेविगलिताचेणीवपुः कंपितं सोरम्भा
दरलोलुपेनमधुपेनापीयदृष्टाधरं।। खिन्नाद्‌गमिमा गधावनपरिच्छेशाहरलपोसिप त्वेकीट प्रति
धनेपप्रिगमानोल्लेपरस्योतिकं। ३५ आयातः सखिदेशात प्रियतमोमघत्वरेवर्त्तितत्वं भूषो
रचपदविप्रसादवतनुं सख्या इदंवा विकं।। आकर्णाजननतः प्रयातुमशाकयानेवमद्यंगरं कृत्वाभूष
णासक्रियाजडतयोतस्याः कुरंगीदृशः ३६ निजविरूपाणि विलोचनवक्रपद्मः सोसिंदूरक

© Dharmartha Trust J&K. Digitized by eGangotri

ज्ञान सुगंधविलिप्तदेहः। स घः अयमहित तएव न वेत्त्रायस्त्वं भ्रातः कथं वमसि माधवमत्समीपे ३७
हस्तद्वयेन परिमृज्य करोषि नेत्रे पंगोप्यसि पठे न किमंगरागं।। मर्च्यहरे चतुरतयमतस्त्वदीया कु
चैवकंडूलकजातववत्राचैद्दे ३८ ...घभ्राम्यण भोजनार्थमुदिते कोतेन देशांतरादापाते मम मे म ३
प्रसुप्तिसमये स्मरदेवतत् किं भवेत्। तेन त्वं कृपया गृहे च लेशं भुज्य हरात्रिवसप्रातः सार्पस्तुपेसया
रूपथिकस्त्वायेद्देशं सुरा ३९ स्थितिः प्रतपिता स्वेन तु परिखंड रश्मिच्छत्रावनं पथिकपनिर्ज
नवसतिरेतिकं मेमता।। जलं पथ्यिन दृश्यते तदिह वाटिकाकूपके दिनं गमय यत्र जे पुन रूपे
हिशुन्येमम ४० पथिकममसुहूर्त्ते दृश्यती द्वेत्रमाया दिह निसुलनिकुंजे पुष्पपुंजे शयामि
।। द्युतिनिकर निषस्से कोपि कापाथमंगभ्रमण गलित कर्णभूषणे वावदाति ४१ स
रविदिनमणि शशांवारुणी लंबमानः समुदयति च पूर्वी मंदमंदं हिमांशुः।। युवतिभिर
विनीता अंचलांतः प्रदीपास्तदपि कठिनमापी नागतः किं सकांतः ४२ शय्या चंदनपं
कशैवलवती गेहे लता मंडपं कस्तूरि घनसार लिप्तकदली कुंदे चंद्रस्थले।। दीपारत्नमया
नेत्रं गलतया सखीजनं सुध्रुवः प्रायः शाम्यति मन्मथाग्नि रमुना त्वामंतरा किं हरे ४३ तस्याः
कथं सुभगसंप्रति वर्णनीया वस्था वियोगजनिता खलु पंचभूते।। दोर्णीन किं तु नयने मधु
तनोर्ध्ववह्नि श्वासानलः समुदभून्नाभ अंगयष्टिः ४४ सेयं पद्मत्रवकल्पित नशाय
न निद्राति शुष्काशयाकंठे भार मियाम्रणालवलतिकाहः ... वाहष्यति।। एलापत्ररुगी

© Dharmartha Trust J&K. Digitized by eGangotri

राम
३

धवान्यमपि नश्रीलाति संधुक्ष एतास्याश्रेष्टितं कथं मृगदृशो बाधायते धुना ४५ तस्मै विवर्तनमनल्पमि
यं करोति द्विधा तिहृदये बाहिरेतियाति॥ श्वासं विमुंचति निर्विनिंदति नामृतांशुभावानुलेवविरहानलकुसुंदरी
ति ४६ अदः कष्टं विनिंतं ज्वलति मम किं तत्र करवै न वा पारावारं किमपि कलयेद्दुःखलघेः॥ त्वोहं त्वां वैदृ
शी कथयतमुपमं सहचरी प्रियः प्रायः प्रायो भवति मम नेत्रातिथिरियं। ४७ अनो विसंतस्य क्षयति मे
म स्वान्तमधुना स्वयं गत्वा दृशां तस्य पद्म नेत्रा सुखमधात्॥ यथास्व प्रारंभमपि वनपुरो याति कपटी समाग
तस्यैवं कलयति नवीरीकरस्थैः ४८ तस्याः स्विद्यन्नदीशरीरगहने वक्रो जेयत्रान्विता रोममाला दृश्यते व
भास्य कमलाकांतप्रवाहो भवत॥ शीते स्ते मृगनाभिवंदनस्तु कर्पूरादिभिः सांप्रतं दुर्भिदं समभूत्तत्त
त्वे विरहे तस्याः कुरंगीदृशः ४९ सांद्रत्वेन सरोजाम्बुजस्य नियतं लावण्यवत्रो पवपुः संचारेषु स्ववाकुम
विलसितो निद्रावधिः। विस्ले षतवकापंजदृशा किं वादृशा यर्पिते अंगः संप्रति कर्तुमिच्छति निज
वस्यां दिने पंचषैः ५० तव गुणगणं नायां प्रस्तुता पाकरा चित्तस्य भंगः प्रियः सहासजे तितं सा
गभंगं। स्मितमुकुलिता स्विद्गात्रं मुहुर्विविक्तजतित पश्चां विस्मसंभुजाद्री ५१ आरक्ते न
यनाम्बुजं वितिलकं भालस्थले कज्जलं तव वक्त्रा हिमांशु रप्यमलिमद्दृष्टमिपत्र वंधोप्युतः॥ प
स्य दंतं वमि दृश्यते रतिगुणस्त्वं गो भूमा को दाग्यमुक्तो मा वद किं तु केन सुधिया राद्धे धिकत्वं कुरे पर
यतः किं नाजानतं निविडम्सुयवं बुवस्य विधौतपाणि वा नीवीनिरसनमुले के दधरणो॥ मदा तवे
तुहृदलस्थलश्रोहि नयनेन बाधनमाले विनरपुरतं संचलन यम ५२ ब्रजे: यावज्ज नो नि शि

© Dharmartha Trust J&K. Digitized by eGangotri

३१

शृंगार ४ थिनायं त्यजताँ जगाँ शरासनं ॥ ५४ ॥ स खिन्नं प्रति नं ह्रज्जामिमानं न मत्तो घ्नमतां मनोरथो मे ५४
वह तावह तां वसन्तवायुः करुता करुता विकाशनम्रः रमतां मे तां प्रियो विदेशे कपनीयस्त्र वि
मत्र विदुवक्रे ५५ कथयस्व खिपुरः प्रियस्य चित्तं मयि सरसं विरसं किमस्ति वा रात्र ॥ सर
चपि परिविप तेन रतो निजमपि हतक थं परस्य पुंसः ५६ अयि गतेऽद्य गते निजलोचने द्विपत्ति
८५ पया मयि किं करे ॥ तदिह मानिनि किं मम निष्फलै रचिवलदान शत ऋतुभिः परेः ५७ अंगे रंगाि
कुचनं विदधीत जाकुवतीरसाम्त्र ज्ञातान्तमस्तकानमव ग्रं एणं दृष्ट्वा रमुदु ॥ ४ ॥ सा त्रं
हसत प्रियस्य दधती दंतावली बिंदिको स्रोमभ्रांतिवशाद्भ्रतरपगमे बाला तु धारायते ५८
हत्वा कांतमनन्यसेवनपरं चाटूक्तिभिः सादरं मानिन्यं कलमतां मानिजसखीसं वेष्टिते
सत्वरं ॥ तस्यास्तत्र पदं पविरचिता कोपा चेतनात्मना स्मेरं द्दी वरलोचना विहसति स्म प्र
८६ हर्षतः ५९ मृगमदं हरसीति दृशाधुना तिमिरं गमदेन कपसीति मुखं परं यदि मुखेन जित
स्तव चंद्रमास्त दिह किं वद चंद्रविलेपनं ६० रतिपतिं दहता विहितं कथं स्मरहरेण तनुः
जगताहितो ॥ जितसुपल्लविशाववदनेन तद्वद खिलं जगदाकुलितीकृतं ६१ नयनयुगल राम ४
मतन्मुद्रसिप्राणकस्य खवन मपि निरुद्धं सकलामित सवाल्य वदन कलितत र्जन्यंबुजाहि
त्वमेवं भव तुमिलतति विसेशापरं किं विधात्री ६२ आयातक पुलिन तिष्ठ दयितेयुधा
भिरास्यीयतां ॥ जक्कामिक वालिशितां बलापर्यामि तीदृकांत वदनाका पंकृते जिहुते ६३

© Dharmartha Trust J&K. Digitized by eGangotri

अस्यानं मुखकारके भवतु ते देशं कृतीसं पुनः पादांभोजयुगं मुरारि विकलं त्वद्गं समालोकये ॥
कालाहं निपति परं तु करणे पादे ध धुना मात्मकाः प्राणाः सार्ध समुत्तमं नर विजहत्वयगेतुं पुरः ६४
कतिपयदिनमध्ये यानि देशान्तरेऽहं समुदितमिति भर्तुः सादराकर्णयं स्याः । केरज जलरुमुल्का
ताचम्हृयांमृगा ह्रोढ्ढलकृलरुतम्रा स्वैरमेवानुपेतुः ६५ तस्याः समीक्ष्य सम्मुखचंद्रबिं
बं बद्धो ज चक्र विपुलं नयो गमे ति । कोनीलि हि चरणयोर्मे कुरे ध्वजेन रोमावली निगडिताक
हलाकरेण ६६ न ध्वांते गिलति प्रघट्टति नवा कोकद्वयं तारका नेवामीलति स्वयं न वि
वसे चास्ताचलेगलति ॥ वैदाम्बुद्युति निर्जितो न भवति प्रातः सुधासागरे कस्मिन्नास्यमु
धेगुरेष जनिन्न! समरयद्वाविधे ६७ कडलं नयनयोरपांगयोश्चंचलत्वमतिके विशेष
कं ॥ सस्मितं मुखमुदीक्ष्य सुभ्रुवो मोहमेति मम मानसं मुहुः ६८ नयनयुगमनल्पमप्यप
कम्यं मुखे तु प्रभुनवैवितं वकोचनी देहकांतिं ॥ त्वयि विकुरविलासं वीक्ष्य मुदो विधानव
सुमुखि वि शालमध्यभागं चकार ६९ कं न्ति विद्रुमे स्वलं चलित र रमुक्तागलं कु
द्वय विकंपनं कचभरस्खलनं छिन्नकं ॥ विनिद्रनयनांबुजं त्रिवलिभन्यवद्द स्यलेपरिभ्रम
जलननजयति साहसं मधुवह ७० चालेन हारेण करेण नामनं तमा क्रांतमत्तोन्मयं ॥
हती गवांके चुककुंभयुगं मुकुंदो धायति वामनेत्रा ७१ गोरांगयष्टि धवलंदुकूले

© Dharmartha Trust J&K. Digitized by eGangotri

श्रृंगार॰ विशालनेत्रा तिलकेन लाटे ॥ बिंबाधरोष्ठी प्रियवादिनी च मृणालविभूषेलसत्करान्वयुक्ता ७२
५ जंबेभ्य सुरसंनिधौ रमणावासिकं शंसति स्फुटं गता गतातद्वानकालि रु कर्णकंडूयनं ॥ क्कणेति
क॰र चैनि कुचान्दूरितमंतस्थ सेनिविशायति नूचठ किं तु कुरंगनेत्रावलात ७३ मायांतमुपेक्षिते
प्रियतम सीसंभाषणाद्वाविलिप्तारब्धुं गेहितुं न वाचि नमितो देहस्तयालिंगने। व्याधूतं मयि
चुंबति स्वं वदनं चोष्ठा मयांत्याज्य हप्रेयस्याविपरीतवित्तितमिदं मर्मानिन॰ ह्रेतति ७४ नि
धायवरसृंगपरम्परागतनुदे शेते तथा नमप्य गलयष्टिकां कुचपुंगति पीडितोरसा। विधायया
नकांचितं वदनेमं [illegible] रहः प्रियतमस्य किं करूणि चुंबति प्रेमणि ७५ तमः
कुमुदबोधवेपतति [illegible] ताराणः स्फुरत्पदिव [illegible] मंजरी सकलातिमंदमिंदीवर ॥ कथं कलति
[illegible] हंसकः स्वनति कांचीलतालतो स्फुरति नः परं न हि च मादृशांयायिनाम् ७६ बोधाक
मित्ति विलवधिरिति उमकुचंद्रेष्विरे फयष्ठली च ष्टुणोति कंजं ॥ स्वैरं तदंबुज हरीपरिया राम
तिदीर्घमन्पकुरंगमना [illegible] पुरुषायितेषु: ७७ [illegible] तिन्दूपुरं करचहरवद्दा न्वि ५
न्वितं दलदलं ति चोलिकानि बद्धनारतं सा ॥ [illegible] तिकंकणं रम्यकं [illegible] हसंवलितो
हिल [illegible] तिसुंदरीरतवितर्पयेप्रेयसः ७८ एकस्मिन्नभवने विलोकमुसहसा न क्रोध
पत्या वितिप्री [illegible] जल्पति तव भ्राता वहिस्तिष्ठति ॥ इत्युक्ते [illegible] तयांगनेन गम
नेस्थी। यामिला पेप्रियः सा [illegible] पिबती [illegible] सुंदरमुरस्थ [illegible] सुंदरः ७९ स्मरे दीव

© Dharmartha Trust J&K. Digitized by eGangotri

लोचनांकुचयुगाभोगमुदन्मध्यमां वक्रे पृथुतिवंदिकां राजमालांहालामृतस्नेहिनीमु॥ नी
लां भोधरकांतिकेरविकुरां वारांगणां बालिकां हित्वा किं उपसिस्त्व चित्तचरणं तोजं बध्वं
स्निः ८० पदमिकमनुनेतुं सांगमं सद्यांकंप्रभवति तंतुणीनालो वनांतः प्रयां॥ तदहमनु
विनोमि प्रायशोनंगरूपी वसति स किल कामः कामिनीलिम्बनेषु ८१ मनसि कठिभाव
कुंतले वक्रभावः कुचयुगदृढभावश्च रूपि प्रांतभावः॥ परमिह तरुणानां मन सानंददायी कु
वलयनयनानां वाविपी मूषभावः ८२ करालितविलोकनप्रसृतया दृशा दीर्घते सखी
मामि सुखी करोस्मृतमालिते मां प्रति॥ तथापि हृदि संमर्दवृहिरुपैति कोपं तथा यतो हिताभि
न स्वप्नमेव तिमा निनिद्रावशः ८३ मार्गेपांसहस्ता विलोकय चलयतंयांतीनमानेत्रणा

सं०६ हस्तेनां घ्रिविमूषणे विघटती चा वा चैसखिवालं यांहिप्रतिमं दिरं सखिधृत
मातृगास्समानीयतामित्थमित्र तया स्थितं च तुरयामस्तु रवे दंभतः ८४ ज्ञातेद्रव कदर्ह
यनन्यानके रुन्मु च्यवीटां पुनः किंचिद्धकितनासिनंन तमुखं सा लारकं ठान्वितं॥ वरा
स्थाईनन्तां कुमिलितफूल्कुसकूपासकंमु चं ताप्रियमे वलनवलतेदृष्ट्याकु चं सुंदरी ८५
स्यामिति वादिनं शुकमनंगमं चालसकें सखीजनपरस्पेव धः कुमिले पादस्था वीक्षते ८६॥

© Dharmartha Trust J&K. Digitized by eGangotri

त्वदीयवि रहाग्निना दहति कांतकांता वधूरनिंद्रनयनांचलाभ यिताव कीनाननाः
कथेद्वतिसत्त्वं ननतवक्रचं शार तेवधू हरिमहान लं परमुपे तिशां तिमया ८७ पांथा
गच्छघनाघनं द्वदनो दारेह वेश्रोत्रं भैरक्षै कामम कालिका चतत्रूरन्वि न्याचम ख्याधिका॥
दृशाहंनिजभावतल्लितनवो दे श्यात्यमूल्याप शया वन्यविधने तथाकुरुमनस्तस्सांकु रंगी
दृशि ८८ चलत्पतिशनालिकास्फुरति चारुबिंबाधरः पतत्पुरसिपंकजंस्थल मूक्तलम्नूल
ता॥ शहातिन चभालिकं मुखमती वशोलमालितं सखे कलयमानसे म्रगदृशास को पक्रमः॥ ८९
केलि तच्चिकुरभारं स्वं विद्युत्लोल्पतसमाधदसजदवतं कर्णमथ्यमगाद्दौ पुरुषसुरतके
लीमंदमंदंचलंती तदिदमनुरहस्यं विस्मरत्याशु कस्य ९० ससितमिह निभयंस्व पदं हे खि
समपगम्य सस्तु धांशुवदनामिति प्रतिङ्क्रियायसखागतं॥ ततः प्रियतमे विशत्य द्रुतनिद्रि
तासावधूः कपोलपुलकैः परं प्रियतमेन कोडीकृता ९१ नाथेन पादनमितेन गतप्र
को पा त्वसाहिकिंनसखि सुंदरि केलिगेहे। प्राप्तः स्मरस्तव सुकृतमिदं विलोकय धन्य
गेहशिथिलमुच्छ्रितिरितिप्रतीमः ९२ अयितहृदि कोपानेवदिना बेसेनः प्रियतवमम
वक्तुकापितल्लासमप्तः। तनुकलिननवतुमह्यं रंजनं देहिमह्येव लिंगिति सुखगो र्दी
कापिद्दूनाहिमिद्राक्षुःल्दि [illegible] व्याविता सुगंधध्वन

तम ६

© Dharmartha Trust J&K. Digitized by eGangotri

ग

मद्धिचकापवननायकांतंद्विता॥ दिनं कसुमजन्मनः स नि [illegible] देशांतरं कथं कथयसी
प्रतंपवतिमानसंनिश्चलं ९४ हरन्नयनम्रदीपाङ्गसमयादनंगस्तदहृदयतिनुदीयात्व
गउलेनोसकामः। यदत्विलज्जनवित्तासोहनंपंकजाद्यानयनयुगलमनसाजनंवामम
स्वाः ९५ गाढांधकाररजनीष्वभिसारिकाणां शंकेतदेशमभिहमलताद्युतीनांदेहच्छविः वि
लसितांबुदवृंदमध्येसौदामिनीवष्टुश्रुमेऽम्बुजलोचनानात् ९६ ध्वनतं विरतंघनः सखिपतंति खा
द्विदवष्ट केदंबवननवासिनः परिवृंहतिमंदानिलाश्च॥ हरंतिहृदयंनुगौरहः शिखंडिनश्चावएकथीमु
गदशासततं प्रियतंविनाजीवनं ९७ एतावद्दिवसावधिप्रकरतारखाननाभेरियंकस्तूरीवरम
चिकासखिवतथावक्षःस्थलोपकंपरं॥ कंदूकाकृतिकंटकांचिनमिदंदृष्ट्वंपुष्पापरंकिंकर्मः क्वनिवेद
यामिबद्धुधारोगोभवःसंजति ९८ प्रियेदद्दलंभुजमास्यबिंबेकुत्तहलेनवविलोकयचित्ते॥ चको
न ५ रैत्रापिसभोपविष्टायकारसांकुंचनमंगुलीनां ९९ स्वेदांबुभिःप्रियविभातिसुखारविंदंकछंम
हाश्रुमवतोश्रुमतोमयूखैः॥ चैत्राचलेनमधुरंतवगंधवाहंदेहेविधातुमितिमज्जनितह्रदोका १००
उदयमपगतेसहस्रभानावपिकिरत्येलसितेगवाहरंध्रे। उषसिचककरीविरुवमानानाशि
वदनाकलुतेंकारमंतः १०१ गंत्राघकवासिनिशिसुंदरिभवंदष्प्राणाधिपस्यवसतिंसखिया
मिद्गणी॥ किंचालिशेनभयमेष्यसहायभूताध्येयंममास्तिबलवन्नसहायभूतं १०२ इदेपरम

© Dharmartha Trust J&K. Digitized by eGangotri

शृंगार
७

सुंदरं तव वपुर्वयो यौवनं तया च सह खेलनं सुभग नैव मे दुःखदं ॥ तथाद्य सुदृशो यथा सुरतकुंजकेलि-
वियोगजनितानलं कलय निर्दयं भवद्गुसहः १०३ दिने नवद्रुनाहठाद्गतिसमागमस्पृशं प्रियस-
सुहृद्दिनं मिलनयात्रया प्रस्थितं ॥ गला च रजनी तयोः रहसि जल्पितो खिद्यं च हृदयं स्वच्छं नंदति
वासितं वायसैः १०४ उद्यत्सजि मलं विधाय सवनं चाध्याय वेलां [illegible] तरे नीलेंदीवरलोचनाक्षकुसु-
मैः यासं व्रयंतीक चानु ॥ कल्यंकं सपरिछदं विदधती सा यं पुनर्मानिनि निद्रातां प्रियसि चागतेति कृति-
नाम त्वे वनीयान् विधिः १०५॥ मंदं मंदमुदेति द्रोचयकच स्वभानुमायाति मां रोमाली भुजगी प्र-
दर्शयि करणत्वाद्देहिकुण्डंगुली ॥ नु संततिप्रकटं यिधोहि नयनद्वारविंदद्वयं न ति कंतत वाधुनेति हि-
रं हेतस्या द्दशा जृंभते १०६ इहावपि कथाद्धसितं भणनं सत्रयत्र प्रियोपदेशसुरभावयि स्व-
गृहमागतो न प्रभुः ॥ इति प्रजल्पितं दुःखिता विरहिणीलपेती मुकुंदमन्हछे सहसा सखीगण-
कृतोपचारापि सा १०७ विलोक्य हृदि वासिनं कृपधिमाकुरंगेक्षणा चलत्सवनकंपिताम्बु-
जदलानुसारीक्षणा ॥ विहृत्य हसितानने चलचलेति चेतोंम्हगजगाद हृदिदं व चक्षु किमयं
मन्नानसात् १०८ तावद्वक्रो कमयं भवत्यविरतं तावन्न वातेधिरे स्नापद्मकेचिद्गुंहनैर्विद-
सितं तावत्स्वकांतेसुखं ॥ तावद्धारि गृहांतरं वनमिव प्रायः कुरंगीदृशां यावत्सुंदरजारनेत्र-
कमलप्रांतैर्नसमेक्षणं १०९ कांते [illegible] तदावीक्षणं कार्यके

राम
७

© Dharmartha Trust J&K. Digitized by eGangotri

लिखितं सदाशिव...

शृंगार ८

त्कैर्हि कृशोदरि तदा वाच्याः कठोरा गिरः॥ सौभाग्यातिशयेन कुप्यसि ममत्वं चेत्तदन्यो मनै
रायातः कथमुत्थिता हि प्रभवः प्रायः कृपासागराः १०१० वक्त्रं किंचिदुदंचितं विलसितं नेत्रे
चलं चंचलं मंदाक्षानतमाननं न वचनं मंदस्मितं विस्मितं॥ इत्येवं वद शिल्पमंबुजदलाक्षे हृद
िप्रेक्षते सा नेदा हृदि मंजुयौवन तयोर्द्वंद्वाभिवंदामहे १०११ नाभीतटांगांतर नीलयष्टिमि
त्ररम्यस्तनेन तु विधत्तकारा॥ कुचाद्रिजाता यमुनेव दुःखा सा या मुनेनाभि वरोमराजिः १०१२
नभ्रुन यति गिरा शोभा मंदमंदं चलं त्याइति वदति हसन्त्या लंग्य हारणाद्भुमंगं॥ नहि नहि नहि वामा
मानव त्साभवान्या मम हृदय सरोजे सानुरागाज्ञ यंतु १०१३ विषयरस निविष्टेनांह सि
ष्वंति संतो विबुधगुरु विहीनं काव्यमापीयतत्वं॥ तूलं कुटिलनेत्रप्रांत चंचत्कटाक्षानहह
मृगदृशां किं ते विहांस स्पर्धा १०१४ यः श्रीमान्नरेशवक्रतिलकश्री बालकृष्णात्मजो
वत्सान्नम किल्विषत्वांनिहपितु वंशितसा मंडले॥ तेनोक्ते कविना चलाल मणिनाशृंगा राम
रकोटहलेका वे खंडमप्ये समाप्तिमगमत्का तोदरी वर्णनं १०१५ निपीय परसिके: सदा
परमतोषमातन्वतां विलोक्य कविभिः परं रचितयुक्तिराकृष्यतां॥ निरीक्ष्य हृदि सु र्मि ८
तं कठिन बुद्धि मिद्दूष्यतां नयापि मम कौतुकं न किल कोपि कोपक्रमः १०१६ इति श्री
कवि पंडित बालकृष्णात्मज कविलाल मणिविरचिते शृंगार कौतूहलाभिधे केन वे
खंडमये काव्ये विविधनायक... समाप्तिमगमत्॥१०१७॥ लिखितं सदाशिव काश्यपेन॥

© Dharmartha Trust J&K. Digitized by eGangotri

१५

ाथितै पं. क

© Dharmartha Trust J&K. Digitized by eGangotri